CHUNILAL GANDHI VIDYABHAVAN
SURAT.

SK

Manuscripts Library
S.D.P.B.

Coll. No. 67

Title DAKSINAMURTI MANTRA VIDHI IN TANTRASARA.

CHUNILAL GANDHI VIDYABHAVAN, SURAT

Shastri Dinmanishankar Pustak-Bhandara

No. : 67. Subject : Tantric Ritual.

Title : Dakṣiṇāmūrtti Mantra vidhi in Tantrasāra.

Author : — Scribe : —

Date of the work : — Date of the Ms. : —

Place of the work : — Place of the Ms. : —

Size : 7.8" x 4.2" Extent : 2 foll.

Language : Sanskrit. Script : Devanāgarī.

Remarks : Complete

रयेत

प्रणवो हृदयं पश्चात्ततो भगवते पदं ॥ ङे॰ तं च दक्षिणामूर्त्तिं मह्यं मेधां प्र
प्रयच्छ गद्यांतोयं द्वाविंशत्यक्षरो मनुः ॥ अस्य पूजाप्रयोगः ॥ प्रातः कृत्वा
दिशैवोक्तपीठं मन्त्रं तं विन्यस्य ऋष्यादिन्यासं कुर्यात् ॥ तद्यथा ॥ शिरसि
चतुर्मुखऋषये नमः ॥ मुखे देवीगायत्रीछंदसे नमः ॥ हृदि दक्षिणामूर्त्तये
देवतायै नमः ॥ ततः करांगन्यासो ॐ आं ह्रीं क्रौं नमः ॐ ईं ह्रीं तर्जनीभ्यां स्वाहा ।
एवं हृदयादि ॥ ततो ध्यानं ॥ वटवृक्षं महोत्कायं पद्मरागफलोज्वलं ॥
नानारत्नमयैः पत्रैर्विचित्रैरुपशोभितं । नवरत्नमहाकल्पैर्लंबमानैर
लंकृतं । विचिंत्य वटमूलस्थं चिंतयेल्लोकनायकं । स्फटिकरजतवर्णं मौ १
क्तिकामक्षमालाममृतकलशविद्याज्ञानमुद्राकराब्जैः । दधतमुरगक

क्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्त्तिमीडे ॥ एवं ध्यात्वा मा
नसैः संपूज्य शंखस्थापनादिशैवोक्तपीठपूजां विधाय पुनर्ध्यात्वा
हनादि पंचपुष्पांजलिपर्यंतं विधायावरणपूजामारभेत । केसरेषु
अग्निनिर्ऋतिवायुईशानकोणेषु मध्ये दिक्षु च ॐ आं हृदयाय नमः ॥
इत्यादिनार्चयेत् । पत्रेषु स्वर्वादि सरस्वत्यै ब्रह्मणे सनकाय सनंद
नाय सनातनाय शुकाय व्यासाय गणेश्वराय तद्बहिः स्वर्वादि सिद्धा
य गंधर्वाय योगीन्द्राय विद्याधराय तद्बहिरिन्द्रादीन् वज्रादींश्चार्चये
त् ततो धूपादि विसर्जनांतं कर्म समापयेत् । अस्य पुरश्चरणे लक्षजपः
तथा च । लक्षमेकं जपेन्मंत्रं ब्रह्मचारी व्रते स्थितः । जुहुयात्सघृतैः पयैर्द्द
शांशं संस्कृतेनले ॥ इति तंत्रसारे दक्षिणामूर्त्तिमंत्रविधिः ॥